M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref. ________

No. Ser. 272

Title: Ashvättha Pujā

Patra

272

अश्वत्थ पूजा। In complete

Ashvattha Pūjā	: Title
	: Author
	: Editor
	: Year, Vols.
	: Publisher
272 : Ends abruptly	: Remarks

॥श्री अथअश्वत्थपूजाप्रारंभः॥श्री

श्रीगणेशायनमः॥ अथअमासोमपूजनं॥ तत्रतावसतिव्रतास्त्रीभर्तुमनुज्ञांगृही
त्वागुरुशुश्रूकास्तबाल्यादिरहितेशुभकालेपूर्वाह्णामावास्यासोमयोगदिनेप्रातस्ति
३ लामलकल्केनस्नात्वागात्रंगंगदक्षिणंसिंचयित्वातिनोदकेनस्नात्वाशुचिःशुक्ल
वासाः॥ सुमुखश्रेयसादिदेशकालौसंकीर्त्यमेइहजन्मनिजन्मांतरेसुखसौभा
ग्यपुत्रपौत्रधनधान्यादिसंततसमृद्ध्यर्थंदौर्भाग्यतादुःखपरिहारार्थंअनेक न
कल्पोक्तफलावाप्त्यर्थंअश्वत्थमूलेश्रीलक्ष्मीनारायणप्रीत्यर्थंदेशकालाद्य
नुसारतयथाशक्तियथामीलितोपचारद्रव्यैःपौराणिकैर्मंत्रैर्ध्यानावाहनादिषो
डशोपचारैःपूजांकरिष्ये॥ तथाचआसनादिकलशशंखघंटापूजांकरिष्ये॥ कलश
पूजांघंटापूजांकृत्वा॥ अपवित्रःपवित्रोवा० अथध्यानं॥ शांताकारं० चतुर्भु १
जंमहाकायंजांबूनदसमप्रभं॥ शंखचक्रगदापद्मरमागरुडसेवितं॥ सेवि
तंमुनिभिर्दिव्यैर्यक्षगंधर्वकिन्नरैः॥ एवंविधंहरिंध्यात्वाततोभजनमारभेत्

ध्यानं॥ एह्येहिश्रीमहाविष्णोस्थानेचास्मिन्स्थिरोभव॥ यावद्व्रतंसमाप्येततावत्वं
संनिधोभव॥ मणिमाणिक्यखचितंरत्नसिंहासनेच्युत॥ रमारमणसंतुष्टस्थी
यतांभक्तवत्सल॥ आसनं॥ विष्णुक्रांतादिसंयुक्तंस्वच्छंगंगोदकंहरेः॥ पाद्या
र्थंस्वीकुरुविभोदयालोजगदीश्वर॥ पाद्यं॥ गंधाक्षतहिरण्याद्यंफलपुष्प
समन्वितं॥ गंगोदकेनतेस्वर्घ्यंदत्तंस्वीकुरुमाधव॥ अर्घ्यं॥ अत्रेनाम्नायमे
पापंपवित्रंतुजगत्त्रये॥ तोयंवरुणदेवसंदत्तंवैप्रतिगृह्यतां॥ आचमनीयं॥
ॐनमोवासुदेवायतत्वज्ञानस्वरूपिणे॥ मधुपर्कंगृहाणेदंगृहाणपुरुषो
त्तम॥ मधुपर्कः॥ गोक्षीरधामदेवेशगोक्षीरेणमयाकृतं॥ स्नपनंदेवदेवेश
गृहाणपरमेश्वर॥ पय॥ दध्नाचैवमहादेवस्नपनंक्रियतेमया॥ गृहाण
त्वमयादत्तंतवप्रीत्यर्थमेवच॥ दधि॥ सर्पिषास्नपनंदेवक्रियतेद्यमया॥ विष्णो॥
गृहाणश्रद्धयादत्तंप्रसन्नोभवसर्वदा॥ घृतं॥ इदंमधुमयादत्तंतवपुष्ट्यर्थ

र्थमेवच॥गृहाणत्वंचदेवेशममशांतिप्रदोभव॥मधु॥सीतयादेवदेवेशस्नपनंक्रि
२ पतेमया॥गृहाणश्रद्धयायुक्तप्रसन्नोभवसर्वदा॥शर्करा॥क्षीरंदधिघृतंक्षौद्रंश
र्करामधुसंयुतं॥पंचामृतेनतेस्नानायश्रीपतेप्रतिगृह्यतां॥पंचामृतं॥गंगा
दितीर्थतोयंचसुगंधैश्चसुवासितं॥स्नानार्थंतेमयानीतंदत्तंविकुरुमाधव
स्नानं॥वस्त्रंपीतांबरंदिव्यंनानावाससुवासितं॥भक्त्यादत्तंमयादेवप्रीत्यर्थं
प्रतिगृह्यतां॥वस्त्रं॥नारायणनमस्तेस्तुत्राहिमांभवसागरात्॥ब्रह्मसू
त्रंसोत्तरीयंगृहाणपुरुषोत्तम॥उपवीतं॥किरीटहारकेयूररत्नकुंडलमेखल
क ना॥ग्रैवेयकौस्तुभहाररत्नकंकणनूपुराः॥आभरणं॥चंदनंमलयोद्भूतंकस्तू
र्यागरुसमन्वितं॥कर्पूरेणचसंमिश्रंश्रीकृष्णानुलेपनं॥गंधं॥अक्षता
श्चसुरश्रेष्ठाःकुंकुमाक्ताःसुशोभनाः॥गृहाणदेवदेवेशमयादत्ताहिभक्
ताः॥अक्षताः॥शतपत्रैःकर्णिकारैश्चंपकैर्मल्लिकादिभिः॥कुसुमानिचमा २

ल्यानिपुष्पाणिप्रतिगृह्यतां॥पुष्पं॥केशवादिनाभिःपूजयेत्॥अथांगपूजा॥कालाय०
शिरःपू०विष्णवे०ललाटं०वह्नये०नेत्रे०रवये०कर्णौ०दांताय०नासापुटं०निशाक
राय०कंठं०रुद्राय०स्कंधौ०शेषाय०बाहू०जगद्व्यापिने०स्तनौ०नैरूपिणे०वक्षस्थ डो
लं०महेश्वराय०उदरं०निरंजनाय०नाभिंपू०प्रपाध्यक्षा०कटिं०विश्वरूपि
णे०गुह्यं०गंजेलभवेन०ऊरूपू०स्वप्रकाशाय०जानुनी०स्वयंज्योतिषे०गुल्फौ०
चर्मद्रहाय०पादौ०जनाश्रयाय०तले०ब्रह्मणे०सर्वांगंपू०अद्येत्यादिदेवगुणविशि॥
ह ममैजन्मनिजन्मांतरेचसुखसौभाग्यानेककल्पोक्तफलावाप्त्यर्थंअश्वत्थमू
ले अमासोमपूजांकरिष्ये॥अश्वत्थमूलेतंडुलपुंजेषुअमासोमप्रतिमां
आवाह्य॥अथध्यानं॥आगच्छदेवदेवेशसौभाग्यफलदायिनी॥स्वं
देहिधनंदेहिपुत्रोदेहिस्कानिभितं॥सितवस्त्रपरीधानांमुक्तामणिवि
भूषितां॥चामरैर्दिव्यमानाचश्वेतछत्रोपशोभितां॥सुप्रसन्नावरदा

करुणार्द्रनिरंतरां॥ भुक्तिमुक्तिप्रदायिन्यै भद्रायै तेनमोनमः॥ शांतिसंतानकारिण्यै
नमस्ते शुद्धमूर्तये॥ ध्यानं॥ गंगाधरशरीरार्द्धधारिणीं लोकमातरं॥ सर्वानंदवि
३ धीनानां सर्वाभरणभूषितां॥ आवाहनं॥ नानारत्नगुणाकीर्णं भूषिताखिल
भूतलं॥ गृह्यतामासनं देवी सकार्पाससपरिछदं॥ आसनं॥ गंगागोदावरीरे
वासरस्वसादितीर्थतः॥ आनीतंमांभसा देवी पाद्यं ते कल्पयाम्यहं॥ पाद्यं॥ अ
र्घ्यं गृहाण भो देवी कुसुमाक्षतसंयुतं॥ मया निवेदितं भक्त्या भर्त्तासहपरि
वृते॥ अर्घ्यं॥ देहि त्वं मम सौभाग्यं भुक्तिमुक्तिप्रदायिनी॥ आचम्यतां जगन्मा
ये गृहाणाचमनीयकं॥ आचमनीयं॥ पंचामृतं मयानीतं पयोदधिघृतं म
धु॥ शर्करागुडसंयुक्तं स्नानार्थं प्रतिगृह्यतां॥ पंचामृतं॥ गंगादिसर्वतीर्थे ३
नांस्कंगंधैश्चसुवासितं॥ स्नानार्थं ते मयानीतं तथात्रांतिंप्रयछते॥ स्नानं॥
शारदेंदुप्रतीकाशां वस्त्रयुग्मं सुशोभिनं॥ क्षीरोदकाभिदं दास्ये गृहाण पर